M. T. B. COLLEGE, SURAT
*Manuscripts Library*
No. Ref.
Ser. 14143
Title Ram Taraka Mantra

1443

M Campbell

| | | | |
|---|---|---|---|
| C | Ram Tarak Mantra | | Title |
| | | | Author |
| | | | Editor |
| Sk | | | Year, Vols. |
| | | | Publisher |
| 1443 | Pages 168 | | Remarks |

मं॰त्र॰
॥२॥

श्रीरामायनमः॥ॐअस्यश्रीरामतारकषडक्षरमंत्रराजस्यब्रह्माऋषिर्गायत्रीछंदःश्रीरा
मोदेवतारांवीजं॥नमःशक्तिः॥रामायेतिकीलकं॥श्रीरामप्रीत्यर्थेजपेविनियोगः॥इ
तिसंकल्पः॥ॐब्रह्मणेऋषयेनमःशिरसि॥ॐगायत्रीछंदसेनमःमुखे॥ॐरामायदे
वतायैनमःहृदि॥ॐरांवीजायनमःगुह्ये॥ॐनमःशक्तयेनमःपादयोः॥ॐरामायकी
लकायनमःसर्वांगे॥इतिऋष्यादिन्यासः॥मंत्रेणवामदक्षिणयोर्विन्यस्य॥ॐरांरीं

राम
॥२॥

रूंरैंरौंरः॥ॐरांअंगुष्ठाभ्यांनमः॥ॐरींतर्जनीभ्यांनमः॥ॐरूंमध्यमाभ्यांनमः॥ॐरैंअ
नामिकाभ्यांनमः॥ॐरौंकनिष्ठिकाभ्यांनमः॥ॐरःकरतलकरपृष्ठाभ्यांनमः॥इत्यंगु
लीन्यासः॥मूलेनव्यापकानंतरं॥ॐरांहृदयायनमः॥ॐरींशिरसेस्वाहा॥ॐरूंशिखा
यैवषट्॥ॐरैंकवचायहुं॥ॐरौंनेत्रत्रयायवौषट्॥ॐरःअस्त्रायफट्॥इतिषडंगन्यासः
ॐरांनमःशिरसि॥ॐरांनमःभ्रूमध्ये॥ॐमांनमःहृदि॥ॐयंनमःनाभौ॥ॐनंनमःगुह्ये

मंत्र०
॥२॥

ॐमंनमःपादयोः॥ इत्यक्षरन्यासः॥ ॐरांनमःशिरसि॥ ॐरामायनमःहृदि॥ ॐनमःनमः
पादयोः॥ इतिपदन्यासः॥ ॐदाशरथाय अंगुष्ठाभ्यांनमः॥ ॐविद्महेतर्जनीभ्यांनमः
ॐसीतावल्लभायमध्यमाभ्यांनमः॥ ॐधीमहिअनामिकाभ्यांनमः॥ ॐतन्नोरामःक-
निष्ठिकाभ्यांनमः॥ ॐप्रचोदयात्करतलकरपृष्ठाभ्यांनमः॥ इतिअंगुलीन्यासः॥ ॐ
दाशरथायहृदयायनमः॥ ॐविद्महेशिरसेस्वाहा॥ ॐसीतावल्लभायशिखायैव

राम
॥२॥

षट्॥ ॐधीमहिकवचायहुं॥ ॐतन्नोरामःनेत्रत्रयायवौषट्॥ ॐप्रचोदयात्अस्त्रायफट्
इतिमंत्रः॥ करषडंगन्यासौमूलमंत्रऋष्यादिकरषडंगन्यासांश्चविधायसूर्य्यमंडलेश्री
रामंध्यायेत्॥ ३॥ ॐदाशरथायविद्महेसीतावल्लभायधीमहितन्नोरामःप्रचोदयात्॥
इतिश्रीरामगायत्रीयथाशक्तिसंजपेत्॥ अथासनमंत्रः॥ ॐपृथ्वीत्वयाधृतालोकादेवि
त्वंविष्णुनाधृता॥ त्वंचधारयमांदेविपवित्रंचासनंकुरु॥ १॥ ॐभूर्भुवःकूर्म्मायनमः॥ ॐपद्मा

मंत्रः

॥३॥

सनायनमः॥ ॐ अपसर्प्पंतु ये भूता ये भूता भूमिसंस्थिताः॥ ये भूता विघ्नकर्त्तारस्ते नस्यंतु
शिव आज्ञया॥२॥ वामहस्तेन वामपादांगुष्ठं गृहीत्वा त्रिभिः भूमिमाहत्य॥ अपवित्रः प
वित्रो वा सर्वावस्थां गतोपि वा॥ यः स्मरेत्पुंडरीकाक्षं स बाह्याभ्यंतरः शुचिः॥१॥ अथाचम्य
अथ जपनिवेदनमंत्रः॥ गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपं॥ सिद्धिर्भवतु मे देव
त्वत्प्रसादान्मयि स्थिते॥३॥ इति सर्वत्र जपांते पठेत्॥ अथ ध्यानं॥ ध्यायेत्कल्पतरोर्मू

राम पू

॥३॥

ले सुवर्णमयमंडपे॥ पुष्पकाख्यविमानांते सिंहासनपरिच्छदे॥ पद्मे वसुदले देवमिंद्रनील
मणिप्रभं॥ वीरासनसमारूढं व्याख्यामुद्रोपशोभितं॥ वामोरुन्यस्तहस्तं सीतालक्ष्मणसं
युतं॥ सर्वाभरणसंपन्नं वर्णालक्ष्मं जपेन्मनुं॥ इति ध्यानं॥ कालांभोधरकांतिकांतमनिशं
वीरासनाध्यासिनं मुद्रां ज्ञानमयीं दधत्तमपरं हस्तांबुजं जानुनि सीतां पार्श्वगतां सरोरुह
करां विद्युन्निभां राघवं पश्यंती॥ मुकुटांगदादिविविधाकल्पोज्ज्वलांगं भजे॥ एवं ध्यात्वा

मंत्र०

॥४॥

मानसैः संपूज्यः ॥ आदौ ऋष्यादिकं न्यासं करशुद्धिमतः परं ॥ अंगुलीव्यापकं न्यासौ हृदया
दिन्यासमएवच ॥ १ ॥ तालत्रयं च दिग्बंधः प्राणायाममतः परं ॥ ध्यानं जागो जपश्चेति सर्वमंत्र
ष्वयं विधिः ॥ २ ॥ न्यासं विना भवेत्मूकः सुप्तस्यादासनं विना ॥ ऋषिर्दैवतछंदोभिः परित्य
क्तो भुजंगमः ॥ ३ ॥ शुभमस्तु ॥ श्रीरामायनमः ॥ मंत्रोद्धारः ॥ रां एकाक्षर मनुः प्रोक्तो यं मंत्र
राजः सुरद्रुमः ॥ १ ॥ राम द्व्यक्षरो मंत्रो मंत्रराजोयं भुक्तिमुक्तिफलप्रदः ॥ २ ॥ ॐ राम ह्रीं राम

राम

॥४॥

श्रीं राम ॥ क्लीं राम ॥ ऐं राम ॥ रां राम ॥ बीजैः क्रमषड्विधः ॥ चत्वारो मंत्रराजस्यात् सर्वाभीष्टफलप्र
दः ॥ ३ ॥ रामचंद्र रामभद्र द्विविधश्चतुरक्षरः ॥ ४ ॥ रामायनमः ॥ ५ ॥ रां रामायनमः ॥ ६ ॥ ॐ रा
मचंद्रायनमः ॥ ॐ रामभद्रायनमः ॥ रामाय हुं फट् स्वाहा ॥ ॐ रां ह्रीं रामायनमः ॥ नमः रामा
य शिवो मा ॥ राममंत्रोयं वसुवर्णो विसुप्रदः ॥ ७ ॥ हुं जानकीवल्लभाय स्वाहा ॥ दशाक्षरोयं मं
त्रः स्यात् ॥ १० ॥ ॐ नमः भगवते रामचंद्राय ॥ ॐ नमः भगवते रामभद्राय ॥ १२ ॥ श्रीरामजय

मंत्र०
॥५॥

रामजयजयराम॥२३॥ॐनमोभगवतेरामायमहापुरुषायनमः॥२४॥विश्वामित्रोमुनिः
रामप्रसन्नवदनायनमः॥२०॥रामभद्रमहेष्वासंरघुवीरनरोत्तमदशास्यांतकमांरक्षदेहि
दापयमेश्रियं॥३१॥ॐनमोभगवतेरघुनंदनायरक्षोघ्नविशदायमधुरप्रसन्नवदनायामि
ततेजसेबलायरामायविष्णवेनमः॥मालामंत्रः॥अथध्यानं॥अयोध्यानगरेरम्येरत्नमं राम
डपमध्यगे॥ध्यायेत्कल्पतरोर्मूलेरत्नसिंहासनंशुभं॥तस्मिन्सिंहासनेरम्येवीरासनस ॥५॥

माश्रितं॥सम्यक्ज्ञानमयीमुद्रांदधानदक्षिणेकरे॥तेजप्रकाशनंवामेजानुमूर्द्धनिधा
यं॥जानकीवल्लभंदेवंद्विभुजंरघुनंदनं॥वसिष्ठवामदेवादिऋषिभिःपरिवारितं॥वाम
भागेसमासीनांसीतांकांचनसन्निभां॥भजंतांकामप्रदानित्यंरक्तोत्पलकरांबुजां॥ल
क्ष्मणंपश्चिमेभागेधृतछत्रंचचामरं॥पार्श्वेभरतशत्रुघ्नौतालवृंतकरावुभौ॥एवंध्यात्वार्च
नंकुर्याज्जपेन्मंत्रंसमाहितः॥एवंध्यात्वामूलमंत्रमष्टोत्तरशतवारंजपित्वा॥श्रीसीता

मंत्र०
॥६॥

लक्ष्मणभरतशत्रुघ्नहनुमन्मंत्रानुद्दशदशसंख्यकाननुक्तदंगलेनजपेत् ॥ तेषांप्रकारमा
ह ॥ श्रीसीतामंत्रस्यजनकायऋषयेनमः शिरसि ॥ गायत्रीछंदसेनमः मुखे ॥ श्रीसी
तादेवतायैनमः हृदये ॥ श्रींबीजायनमः गुह्ये ॥ स्वाहाशक्तयेनमः पादयोः ॥ श्रीसी
ताप्रीत्यर्थेजपेविनियोगः ॥ इतिकृतांजलिर्वदेत् ॥ इतिऋष्यादिन्यासंकृत्वा ॥ श्रां
हृदयायनमः ॥ श्रींशिरसेस्वाहा ॥ श्रूंशिखायैवषट् ॥ श्रैंकवचायहुं ॥ श्रौंनेत्रत्रयाय

राम
॥६॥

वौषट् ॥ श्रः अस्त्रायफट् ॥ इतिमंत्रैः करषडंगन्यासौविधाय ॥ ध्यायांदक्षिणपाणौ
दधतींरक्तांबुजंस्वर्णाभांरामंविलोकयंतीमतभकासनस्थांसीतां ॥ इतिध्यात्वामं
त्रंजपेत् ॥ श्रीलक्ष्मणमंत्रस्यअगस्त्यऋषयेनमः शिर ॥ गायत्रीछंदसेनमः मुखे ॥ श्री
लक्ष्मणदेवतायैनमः हृदये ॥ लंबीजायनमः गुह्ये ॥ नमः शक्तयेनमः पादयोः ॥ पुरुषार्थ
चतुष्टयेविनियोगः ॥ इतिकृतांजलिर्वदेत् ॥ इतिऋष्यादिन्यासंकृत्वा ॥ लांहृदयायन

मंत्र०
॥७॥

मः॥लींशिरसेस्वाहा॥लूंशिखायैवषट्॥लैंकवचायहुं॥लौंनेत्रत्रयायवौषट्॥लःअ
स्त्रायफट्॥इतिमंत्रैःकरांगन्यासौविधाय॥अथध्यानं॥द्विभुजंस्वर्णाभंचिरतनुंपद्म
निभेक्षणंधनुर्बाणधरंराममेवासंसक्तमानसं॥इतिध्यात्वामनुंजपेत्॥भरतस्यैवमे
वमाज्ञातशत्रुघ्नस्यापिअयंविधिः॥ध्यायेन्नीलवर्णौ॥अथश्रीहनुमत्मंत्रस्यईश्वरऋ
षिरनुष्टुप्छंदः॥श्रीहनुमान्परमात्मादेवता॥हंबीजं॥स्वाहाशक्तिः॥हाहाकीलकं

राम
॥७॥

श्रीहनुमत्प्रीत्यर्थेजपेविनियोगः॥ईश्वरऋषयेनमःशिरसि॥अनुष्टुप्छंदसेनमःमुखे
श्रीहनुमतदेवतायैनमःहृदि॥हंबीजायनमःगुह्ये॥स्वाहाशक्तयेनमःपादयोः॥हाहा
कीलकायनमःसर्वांगे॥इतिकृतांजलिर्वदेत्॥ॐआंजनेयायहृदयायनमः॥ॐरुद्रमूर्तये
नमःसिरसेस्वाहा॥ॐवायुपुत्रायनमःशिखायैवषट्॥ॐअग्निगर्भायनमःकवचायहुं॥ॐ
रामदूतायनमःनेत्रत्रयायवौषट्॥ॐब्रह्मास्त्रनिवारणायनमःअस्त्रायफट्॥इतिकरांगन्या

मंत्र०

॥ ८ ॥

सोविधाय ॥ दहनतप्तसुवर्णसमंप्रभंभयहृदंहृदये विहितांजलिं ॥ श्रवणकुंडलशोभिमुखांबु
जंनमतवानरराजमहाद्भुतं ॥ एवंध्यात्वा ॥ हंनमोभगवतेआंजनेयमहाबलायस्वाहा ॥ इति
जपेत् ॥ पुनःप्राणायामऋष्यादिन्यासपूर्वकं ॥ जपमालांशिरसिधार्य्यः ॥ अर्घोदकमाद
य ॥ पुंडरीकाक्षं विस्वात्मन्मंत्रमूर्त्तेजनार्दन ॥ गृहाणोमंजपंनाथमयदीनस्यशाश्वते ॥ इत्यु
च्चार्यमूलमंत्रंचदेवस्यहस्तेगृहीतोदकदानेनजपंसमर्प्य ॥ जपमालांसंपूज्यरहसिधारये

राम

॥ ८ ॥